
कविकुलगुरु - कालिदास - संस्कृत - विश्वविद्यालयः

कविकुलगुरु कालिदास संस्कृत विश्वविद्यालय, रामटेक
हस्तलिखित संग्रह

दाखल क्र M745 विषय वैदिक

नाव. यजुर्वेद (शुक्ल, संहिता पाठ) अध्याय १६

लेखक/लिपीकार शिवरामभट धामनकर

पृष्ठ ५१ काळ — पूर्ण/अपूर्ण

[illegible]

स

॥श्री गणेशाय नमः॥ श्री सरस्वत्यै नमः॥ श्री गुरुभ्यो नमः॥ श्रीसां
ब॥ ॥हरिः॥ ॐ॥ ॥ ७॥ एष ते निरृते भागस्तं जुषस्व स्वा
हाग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा यमनेत्रेभ्यो देवेभ्यो
दक्षिणासद्भ्यः स्वाहा॥ विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात्सद्भ्यः
स्वाहा मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य उत्त
रसद्भ्यः स्वाहा॥ सोमनेत्रेभ्यो देवेभ्य उपरिषद्भ्यो दुव
स्वद्भ्यः स्वाहा॥१॥ ये देवा अग्निनेत्राः पुरसदस्तेभ्यः स्वाहा ये
देवा यमनेत्रा दक्षिणासदस्तेभ्यः स्वाहा॥ ये देवा विश्वदेवने

त्राः पश्चात्सदस्तेभ्यः स्वाहा ये देवा मित्रावरुणनेत्रा वा म
रुन्नेत्रा वोत्तरसदस्तेभ्यः स्वाहा॥ ये देवाः सोमनेत्रा उ
परिषदो दुवस्वन्तस्तेभ्यः स्वाहा॥२॥ अग्ने सहस्व पृत
ना अभिमातीरपास्य॥ दुष्टरस्तरन्नरातीर्वर्चो धा
यज्ञवाहसि॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णो हस्ताभ्याम्॥३॥ उपांशोर्वीर्येण जुहोमि हतं
रक्षः स्वाहा॥ रक्षसां त्वा वधायावधिष्म रक्षोऽमुष्य त्वा
वधायामुमवधिष्म॥ जुष्टा लोको ज्यस्य वेतु स्वाहा॥ ॥४॥

अपो देवा मधुमतीरगृभ्णन्नूर्जस्वती राजस्वश्चितानाः ॥
याभिर्मित्रावरुणावभ्यषिंचन्याभिरिंद्रमनयन्नत्य
रातीः ॥ १ ॥ वृष्ण ऊर्मिरसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा वृ
ष्ण ऊर्मिरसि राष्ट्रदा राष्ट्रममुष्मै देहि ॥ वृषसेनोसि रा
ष्ट्रदा राष्ट्रं मे देहि स्वाहा वृषसेनोसि राष्ट्रदा राष्ट्रममु
ष्मै देहि ॥ अर्थेतस्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहार्थेतस्थ रा
ष्ट्रदा राष्ट्रममुष्मै दत्त ॥ ओजस्वतीस्थ राष्ट्रदा राष्ट्रं मे दत्त
स्वाहौजस्वतीस्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥ आपः परिवाहि

णीस्थ राष्ट्रदा राष्ट्रं मे दत्तः स्वाहा पः परिवाहिणीस्थ राष्ट्र
दा राष्ट्रममुष्मै दत्त ॥ अपां पतिरसि राष्ट्रदा राष्ट्रं मे देहि स्वा
हा पां पतिरसि राष्ट्रदा राष्ट्रममुष्मै देहि ॥ अपां गर्भोसि राष्ट्र
दा राष्ट्रं मे देहि स्वाहा पां गर्भोसि राष्ट्रदा राष्ट्रममुष्मै देहि ॥ सू
र्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा सूर्यवर्चस स्थ राष्ट्रदा रा
ष्ट्रममुष्मै दत्त ॥ सूर्यत्वच स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा सूर्यत्व
च स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥ व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे
दत्त स्वाहा व्रजक्षित स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥ वाशा स्थ रा

ष्ट्रदा राष्ट्रं मे दत्त स्वाहा वाशा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥ मांदा स्थ
राष्ट्रदा राष्ट्रं मे दत्त स्वाहा मांदा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥ राक्वरी
स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा राक्वरी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥
जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा जनभृत स्थ राष्ट्रदा रा
ष्ट्रममुष्मै दत्त ॥ विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा विश्व
भृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥ रौष्ठा स्थ राष्ट्रदा राष्ट्रं मे द
त्त स्वाहा रौष्ठा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥ आपः स्वारा

जी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त ॥ ७ ॥ सं मधुमतीर्मधुमतीभ्यः पृ
च्यंतां महि क्षत्रं क्षत्रियाय वन्वानाः ॥ अनाधृष्टाः सीदत सहौज
सा महि क्षत्रं क्षत्रियाय दधती ॥ ४ ॥ सविता त्वा प्रसवानां सुव
तामग्निर्गृहपतीनां सोमो वनस्पतीनाम् ॥ बृहस्पतिर्वाच
इन्द्रो ज्यैष्ठ्याय रुद्रः पशूनां मित्रः सत्यो वरुणो धर्मपतीनाम् ॥
॥ ९ ॥ इमं देवा असपत्नं सुवध्वं महते क्षत्राय महते ज्यैष्ठ्या
य ॥ इममुममुष्य पुत्रममुष्याः पुत्रमस्यै विशे ॥ १० ॥ एष वः कु
रवो राजैष वः पंचाला राजा ॥ सोमोऽस्माकं ब्राह्मणानां राजा ॥

॥७॥

सोमस्य त्विषिरस्यग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वा
हा॥ पूष्णे स्वाहा बृहस्पतये स्वाहा॥ १३॥ इन्द्राय स्वाहाऽंशाय स्वाहा
श्लोकाय स्वाहा घोषाय स्वाहा भगाय स्वाहार्यम्णे स्वाहा॥ सवितु
र्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः॥ अनिभृ
ष्टमसि वाचो बन्धुस्तपोजाः सोमस्य दात्रमसि स्वाहा राजस्वः॥
सधमादो द्युम्निनीराप एता अनाधृष्टा अपस्यो वसानाः॥ प
स्त्यासु चक्रे वरुणः सधस्थमपां शिशुर्मातृतमास्वन्तः॥ १४॥
क्षत्रस्योल्बमसि क्षत्रस्य जराय्वसि क्षत्रस्य नाभिरसि

॥७॥

क्षत्रस्य योनिरसि॥ इन्द्रस्य वार्त्रघ्नमसि त्वया यं वृत्रं वध्यात् मित्रस्या
सि वरुणस्यासि॥ १५॥ रुजासि दृवासि क्षुमासि॥ पातैनं प्राञ्चं पातै
नं प्रत्यञ्चं पातैनं तिर्यञ्चं दिग्भ्यः पात॥ १६॥ आविर्मर्या आवित्तो
अग्निर्गृहपतिरावित्त इन्द्रो वृद्धश्रवाः आवित्तः पूषा विश्ववेदाः
आवित्तौ मित्रावरुणौ धृतव्रतौ॥ आवित्ते द्यावापृथिवी विश्वशंभु
आवित्तादितिरुरुशर्मा॥ १७॥ अवेष्टा दन्दशूकाः प्राचीमारोह गा
यत्री त्वावतु॥ रथन्तरं साम त्रिवृत्स्तोमो वसन्त ऋतुर्ब्रह्म द्रवि
णम्॥ १८॥ दक्षिणामारोह त्रिष्टुप् त्वावतु॥ बृहत्साम पञ्चदशस्तो

मो.२

मो ग्रीष्म ऋतु क्षत्रं द्रविणम् ॥ ९ ॥ प्रतीचीमारोह जगती त्वावतु ॥ वैरूप
ᳪ सामसप्तदशस्तोमो वर्षा ऋतुर्विड् द्रविणम् ॥ उदीचीमारोहानुष्टुप्त्वावतु ॥
वैराजᳪ सामैकविᳪ शस्तोमः शरदृतुः फलं द्रविणम् ॥ १० ॥ ऊर्ध्वा
मारोह पङ्क्तिस्त्वावतु ॥ शाक्वररैवते सामनी त्रिणवत्रयस्त्रिᳪ शौ स्तो
मौ हेमन्तशिशिरावृतू वर्चो द्रविणम् ॥ प्रत्यस्तं नमुचेः शिरः ॥ ११ ॥ सोम
स्य त्विषिरसि तवेव मे त्विषिर्भूयात् ॥ मृत्योः पाह्योजोसि सहोस्यमृत
मसि ॥ १२ ॥ हिरण्यरूपा उषसो विरोक उभाविन्द्रा उदितः सूर्यश्च ॥ आ
रोहतं वरुण मित्र गर्तं ततश्चक्षाथामदितिं दितिं च ॥ मित्रोसि वरुणोसि ॥ १३ ॥ ५४

सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्यग्नेर्भ्राजसा सूर्यस्य वर्चसा ॥ इन्द्रस्ये
न्द्रियेण मरुतामोजसा क्षत्राणां क्षत्रपतिरेध्यति दिद्यून्पाहि ॥ १५ ॥ इमं
देवा असपत्नᳪ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जान
राज्याय ॥ इमममुष्य पुत्रममुष्यै पुत्रमस्यै विशे ॥ १६ ॥ एष वः कुर
वो राजैष वः पञ्चाला राजा ॥ सोमोस्माकं ब्राह्मणानाᳪ राजा ॥ १७ ॥

२५

प्र पर्वतस्य वृषभस्य पृष्ठान्नावश्चरन्ति स्वसिच इयानाः ॥ ता आववृत्र
न्नधराग्नुदक्ता अहिं बुध्न्यमनु रीयमाणाः ॥ विष्णोर्विक्रमण
मसि विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसि ॥ १८ ॥ प्रजापते न त्वदे
तान्यन्यो विश्वा रूपाणि परि ता बभूव ॥ यत्कामास्ते जुहुमस्तन्नो

हि॥

अस्थ्नो वृत्रस्य स्यामपत्येयोरवीलाम ॥रुणा रुद्र यत्ते क्रवि परं नाम ॥ तस्मै हुतमसि यमेष्टमसि स्वाहा ॥२०॥ इन्द्रस्य वज्रोसि मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मि ॥ अव्यथायै त्वा स्वधायै त्वारिष्टः फल्गुनः ॥ मरुतां प्रसवेन जयापाम मनसा समिन्द्रियेण ॥२१॥ मा त इन्द्र ते वयं तुराषाळयुक्तासो अब्रह्मता विदसाम ॥ तिष्ठा रथमधि यद्वज्रहस्ता रश्मीन्देव यमसे स्वश्वान् ॥२२॥ अग्नये गृहपतये स्वाहा सोमाय वनस्पतये स्वाहा ॥ इन्द्रस्येन्द्रियाय स्वाहा मरुतामोजसे स्वाहा ॥ पृथिवी मातर्मा मा हिंसीर्मो अहं त्वाम् ॥२३॥ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ॥

॥हि५॥

नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥२४॥ इयदस्यायुरस्यायुर्मे देहि युङ्ङसि वर्चोसि वर्चो मे देहि ॥ ऊर्गस्यूर्जं मयि धेहीन्द्रस्य वां वीर्यकृतो बाहू अभ्युपावहरामि ॥२५॥ स्योनासि सुषदासि क्षत्रस्य योनिरसि ॥ स्योनामासीद सुषदामासीद क्षत्रस्य योनिमासीद ॥२६॥ निषसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः ॥२७॥ अभिभूरस्येतास्ते पञ्च दिशः कल्पन्ताम् ॥ ब्रह्मंस्त्वं ब्रह्मासि ॥२८॥ सवितासि सत्यप्रसवो वरुणोसि सत्यौजा ॥ इन्द्रोसि विशौजा रुद्रोसि सुशेवः ॥२९॥

पा२

त३

वि

॥८॥

हरिः ॐ॥ युंजानः प्रथमं मनस्तत्वाय सविता धियः॥ अग्नेर्ज्योतिर्निचाय्य
पृथिव्या अध्याभरत्॥१॥ युक्तेन मनसा वयं देवस्य सवितुः सवे॥ स्व
र्ग्याय शक्त्या॥ युक्त्वाय सविता देवान्त्स्वर्यतो धिया दिवम्॥ बृहज्ज्योतिः
करिष्यतः सविता प्रसुवाति तान्॥३॥ युंजते मन उत युंजते धियो विप्रा विप्र
स्य बृहतो विपश्चितः॥ वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः
परिष्टुतिः॥४॥ युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः॥ शृ
ण्वंतु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः॥५॥ यस्य प्रया
णमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा॥ यः पार्थिवानि विममे स एतशो

वि

रजांसि देवः सविता महित्वना॥६॥ देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय॥ दि
व्यो गंधर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदतु॥७॥ इमं नो देव सवित
र्यज्ञं प्रणय देवाव्यं सखिविदं सत्राजितं धनजितं स्वर्जितम्॥ ऋचा स्तोमं समर्ध
य गायत्रेण रथंतरं बृहद्गायत्रवर्तनि स्वाहा॥८॥ देवस्य त्वा सवितुः प्रसवे
ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्॥ आददे गायत्रेण छंदसांगिरस्वत्॥ पृथिव्याः
सधस्थादग्निं पुरीष्यमंगिरस्वदाभर॥ त्रैष्टुभेन छंदसांगिरस्वत्॥९॥
अभ्रिरसि नार्यसि त्वया वयमग्निं शकेम खनितुम्॥ सधस्थ आ जागतेन
छंदसांगिरस्वत्॥१०॥ हस्त आधाय सविता बिभ्रदभ्रिं हिरण्ययीम्॥ अ
ग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरदानुष्टुभेन छंदसांगिरस्वत्॥११॥

११०॥

श्च१

नमः॥ ९८॥ आ विश्वतः प्रत्यंचं जिघर्म्यरक्षसा मनसा तज्जुषेत ॥ मर्यश्रीः स्पृहयद्व
र्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥ २४॥ परि वाजपतिः कविरग्निर्हव्या
न्यक्रमीत्। दधद्रत्नानि दाशुषे ॥ २५॥ परि त्वाग्ने पुरं वयं विप्रं सहस्य धीम
हि। धृषद्वर्णं दिवेदिवे हन्तारं भंगुरावताम् ॥ २६॥ त्वमग्ने द्युभिस्त्वमाशुशु
क्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि॥ त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जा
यसे शुचिः ॥ २७॥ ध्र॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो
हस्ताभ्याम्॥ पृथिव्याः सधस्थादग्निं पुरीष्यमंगिरस्वत्खनामि॥
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमजस्रेण भानुना दीद्यतम्॥ शिवं प्रजाभ्यो
हिंसन्तं पृथि[illegible] पुरीष्यमंगिरस्वत्खनामः ॥ २९॥ अपां पृष्ठ
२१

११०॥

मसि योनिरग्ने[illegible] नम्॥ वर्धमानो महाँ आ च पुष्करे दि
२२ वो मात्रया वरिम्णा प्रथस्व ॥ शर्म च स्थो वर्म च स्थोऽच्छिद्रे बहुले उभे॥ व्यचस्व
ती संवसाथां भृतमग्निं पुरीष्यम् ॥ ३०॥ संवसाथां स्वर्विदा समीची उर
सा त्मना॥ अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमित्॥ पुरीष्योऽसि वि
त्वा ५ श्वभरा अथर्वा त्वा प्रथमो निरमन्थदग्ने ॥ ३१॥ त्वामग्ने पुष्करादध्यथर्वा निर
मन्थत ॥ मूर्ध्नो विश्वस्य वाघतः ॥ ३२॥ तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथ थ६
र्वणः ॥ वृत्रहणं पुरन्दरम् ॥ ३३॥ तमु त्वा पाथ्यो वृषा समीधे दस्युह
न्तमम् ॥ धनंजयं रणेरणे ॥ ३४॥ सीद होतः स्व उ लोके चिकित्वा
न्सादया यज्ञं सुकृतस्य योनौ ॥ देवावीर्देवान्हविषा यजास्य

ग्नेबृहद्यजमानेवयोधाः॥३५॥निहोताहोतृषदनेविदानस्त्वेषोदीदि
वाँऽअसदत्सुदक्षः॥अदब्धव्रतप्रमतिर्वसिष्ठःसहस्रंभरःशु
चिजिह्वोअग्निः॥३६॥सꣳसीदस्वमहाँऽअसिशोचस्वदेववीतमः॥
विधूममग्नेअरुषंमियेध्यसृजप्रशस्तदर्शतम्॥३७॥अपो
मं५ देवीरुपसृजमधुमतीरयक्ष्मायप्रजाभ्यः॥तासामास्थानादुज्जिहतामो
षधयःसुपिप्पलाः॥३८॥संतेवायुर्मातरिश्वादधातूत्तानायाहृदयं ना५
यद्विकस्तम्॥योदेवानांचरसिप्राणथेनकस्मैदेववषडस्तुतुभ्यम्॥
॥३९॥सुजातोज्योतिषासहशर्मवरूथमासदत्स्वः॥वासोअग्ने वर
सः१

विश्वरूपꣳसंव्ययस्वविभावसो॥४०॥उदुतिष्ठस्वध्वरावानोदेव्याधि
या॥दृशेचभासाबृहतासुशुक्वनिराग्नेयाहिसुशस्तिभिः॥४१॥ऊ
र्ध्वऊषुणऊतयेतिष्ठादेवोनसविता॥ऊर्ध्वोवाजस्यसनितायदंजिभि
र्वाघद्भिर्विह्वयामहे॥४२॥सजातोगर्भोअसिरोदस्योरग्नेचारु
र्विभृतओषधीषु॥चित्रःशिशुःपरितमाꣳस्यक्तून्प्रमातृभ्योअ
धिकनिक्रदद्गाः॥४३॥स्थिरोभववीड्वङ्गआशुर्भववाज्यर्वन्॥
पृथुर्भवसुषदस्त्वमग्नेःपुरीषवाहनः॥४४॥शिवोभवप्रजाभ्योमा
नुषीभ्यस्त्वमङ्गिरः॥माद्यावापृथिवीअभिशोचीर्मान्तरिक्षंमाव
मं१

नस्पतीन्॥८॥प्रैतुवाजीकनिक्रदन्नानदद्रासभस्पत्वा॥भरन्न
ग्निंपुरीष्यंमापाद्यायुषःपुरा॥९॥वृषाग्निंवृषणंभरन्नपांगर्भंस
मुद्रियम्॥अग्नआयाहिवीतये॥ऋतंसत्यमृतंसत्यमग्निंपुरी
ष्यमंगिरस्वद्भरामः॥१०॥ओषधयःप्रतिमोदध्वमग्निमेतंशिवमा
यंतमभ्यत्रयुष्माः॥व्यस्यन्विश्वाअनिराअमीवानिषीदन्नोअ
पदुर्मतिंजहि॥ओषधयःप्रतिगृभ्णीतपुष्पवतीःसुपिप्पलाः॥
अयंवोगर्भऋत्वियःप्रत्नंसधस्थमासदत्॥१२॥विपा
जसापृथुनाशोशुचानोबाधस्वद्विषोरक्षसोअमीवाः॥
१३

सुशर्मणोबृहतःशर्मणिस्यामग्नेरहंसुहवस्यप्रणीतौ॥१४॥
आपोहिष्ठामयोभुवस्तानऊर्जेदधातन॥महेरणायचक्षसे॥१५॥
योवःशिवतमोरसस्तस्यभाजयतेहनः॥उशतीरिवमातरः॥१६॥तस्मा
अरंगमामवोयस्यक्षयायजिन्वथ॥आपोजनयथाचनः॥१७॥मि
त्रःसंसृज्यपृथिवींभूमिंचज्योतिषासह॥सुजातंजातवेदसमयक्ष्मा
यत्वासंसृजामिप्रजाभ्यः॥१८॥रुद्राःसंसृज्यपृथिवींबृहज्ज्योतिः
समीधिरे॥तेषांभानुरजस्रइच्छुक्रोदेवेषुरोचते॥१९॥संसृष्टांवसुभी
रुद्रैर्धीरैःकर्मण्यांमृदम्॥हस्ताभ्यांमृद्वींकृत्वासिनीवालीकृणोतु

तुतामू॥५५॥सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा॥ सा तुभ्यमदिते मह्योखां दधातु ह
स्तयोः॥५६॥उखां कृणोतु शक्त्या बाहुभ्यामदितिर्धिया॥माता पुत्रं यथोपस्थे साग्निं
बिभर्तु गर्भ आ॥५७॥मखस्य शिरोसि॥वसवस्त्वा कृण्वंतु गायत्रेण छंदसांगिरस्वद्ध्रु
वासि पृथिव्यसि॥धारया मयि प्रजां२ रायस्पोषं गौपत्यं२ सुवीर्यं२ सजातान्यज
मानाय॥रुद्रास्त्वा कृण्वंतु त्रैष्टुभेन छंदसांगिरस्वद्ध्रुवास्यंतरिक्षमसि॥धारया
मयि प्रजां२ रायस्पोषं गौपत्यं२ सुवीर्यं२ सजातान्यजमानाय॥आदित्यास्त्वा कृ
ण्वंतु जागतेन छंदसांगिरस्वद्ध्रुवासि द्यौरसि॥धारया मयि प्रजां२ रायस्पोषं
गौपत्यं२ सुवीर्यं२ सजातान्यजमानाय॥विश्वेत्वा देवा वैश्वानराः कृण्वंत्वानुष्टु
भेन छंदसांगिरस्वद्ध्रुवासि दिशोसि॥धारया मयि प्रजां२ रायस्पोषं गौपत्य

+मीँ२ सजा~

न्सुवीर्यं२ सजातान्यजमानाय॥अदितिष्टे बिलं गृभ्णातु॥५९॥कृत्वाय सा म
हीमुखां मृन्मयीं योनिमग्नये॥पुत्रेभ्यः प्रायच्छददितिः श्रपयानिति॥६०॥वसवस्त्वा धू
पयंतु गायत्रेण छंदसांगिरस्वद्रुद्रास्त्वा धूपयंतु त्रैष्टुभेन छंदसांगिरस्वत्॥आदित्यास्त्वा
धूपयंतु जागतेन छंदसांगिरस्वद्विश्वेत्वा देवा वैश्वानरा धूपयंत्वानुष्टुभेन छंदसांगिर
स्वत्॥इंद्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयतु॥६१॥अदितिष्ट्वा दे
वी विश्वदेव्यावती॥पृथिव्याः सधस्थे अंगिरस्वत्खनत्ववट॥६१॥देवानां त्वा पत्नी
र्देवीर्विश्वदेव्यावतीः॥पृथिव्याः सधस्थे अंगिरस्वद्दधतूखे॥धिषणास्त्वा देवी
र्विश्वदेव्यावतीः॥पृथिव्याः सधस्थे अंगिरस्वदभीधतामुखे॥वरूत्रीष्ट्वा दे
वीर्विश्वदेव्यावतीः॥पृथिव्याः सधस्थे अंगिरस्वच्छ्रपयंतूखे॥ग्नास्त्वा देवीर्वि

इ८२

या३

म्बा४

दे२+

श्वदेव्यावतीः॥पृथिव्याः सधस्थे अंगिरस्वत्पचंतूखे॥ जनयस्त्वाच्छिन्नपत्रा दे
वीर्विश्वदेव्यावतीः॥पृथिव्याः सधस्थे अंगिरस्वत्पचंतूखे॥२॥ मित्रस्य चर्ष
णीधृतो वो देवस्य सानसि॥ द्युम्नं चित्रश्रवस्तमम्॥३॥ देवस्त्वा सवितोद्वपतु
सुपाणिः स्वंगुरिः सुबाहुरुत शक्त्या॥ अव्यथमाना पृथिव्यामाशा दिश
आपृण॥४॥ उत्थाय बृहती भवोदु तिष्ठ ध्रुवा त्वं॥ मित्रैतां त उखां प
रिददाम्यभित्त्या एषा मा भेदि॥५॥ वसवस्त्वाच्छृंदंतु गायत्रेण छंदसां
गिरस्वद्रुद्रास्त्वाच्छृंदंतु त्रैष्टुभेन छंदसांगिरस्वत्॥ आदित्यास्त्वाच्छृंदंतु सा ८
जागतेन छंदसांगिरस्वद्विश्वे त्वा देवा वैश्वानरा आच्छृंदंत्वानुष्टुभे त्वा २
न छंदसांगिरस्वत्॥६॥७॥ आकूतिमग्निं प्रयुजं स्वाहा मनो मेधाम

ग्निं प्रयुजं स्वाहा॥ चित्तं विज्ञातमग्निं प्रयुजं स्वाहा वाचो विधृतिमग्निं प्रयुजं
स्वाहा॥ प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा॥ विश्वो देवस्य नेतुर्मर्तो
वुरीत सख्यम्॥ विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा॥२॥ मा सु
भित्था मा सु रिषोंब धृष्णु वीरयस्व सु॥ अग्निश्चेदं करिष्यथः॥३॥ दृंहस्व
देवि पृथिवि स्वस्तय आसुरी माया स्वधया कृतासि॥ जुष्टं देवेभ्य इदमस्तु
हव्यमरिष्टा त्वमुदिहि यज्ञे अस्मिन्॥४॥ द्रवन्नः सर्पिरासुतिः प्रत्नो होता
स ८ वरेण्यः॥ सहसस्पुत्रो अद्भुतः॥५॥ परस्या अधि संवतोवराँ अभ्यातर॥
यत्राहमस्मि तां अव॥६॥ परमस्याः परावतो रोहिदश्व इहागहि॥ पुरीष्यः
पुरुप्रियोग्ने त्वं तरा मृधः॥७॥ यदग्ने कानि कानि चिदा ते दारूणि दध्म

पे २

मि॥ सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य॥ ७३॥ यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति। सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य॥ ७४॥ अहरहरप्रयावं भरन्तोश्वायेव तिष्ठते घासमस्मै॥ रायस्पोषेण समिषा मदन्तो ग्ने मा ते प्रतिवेशा रिषाम॥ ७५॥ नाभा पृथिव्याः समिधाने अग्नौ रायस्पोषाय बृहते हवामहे। इरंमदं बृहदुक्थं यजत्रं जेतारमग्निं पृतनासु सासहिं॥ ७६॥ याः सेना अभीत्वरीराव्याधिनीरुगणा उत॥ ये स्तेना ये च तस्करास्ताꣳस्ते अग्नेपिदधाम्यास्ये॥ ७७॥ दंष्ट्राभ्यां मलिम्लूञ्जम्भ्यैस्तस्कराꣳउत॥ हनुभ्याꣳ स्तेनान्भगवस्ताꣳस्त्वं खाद सुखादितान्॥ ७८॥ ये जनेषु मलिम्लव स्तेनासस्तस्करा वने॥ ये कक्षेष्वघायवस्ताꣳस्ते दधामि जंभयोः॥ ७९॥ यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः॥ निन्दाद्यो अस्मान्धिप्साच्च सर्वं तं मस्मसा कुरु॥ ८०॥ संशितं मे ब्रह्म संशितं वीर्यं बलं॥ संशितं क्षत्रं जिष्णु यस्याहमस्मि पुरोहितः॥ ८१॥ उदेषां बाहू अतिरमुद्वर्चो अथो बलं॥ क्षिणोमि ब्रह्मणामित्रानुन्नयामि स्वाꣳ अहं॥ ८२॥ अन्नपतेन्नस्य नो देह्यनमीवस्य शुष्मिणः॥ प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे॥ विश्वकर्मणे स्वाहा॥ ८३॥ पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः॥ घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः स्वाहा॥ ८४॥ ८४॥ इति द्वितीयोध्यायः समाप्तः॥ अध्या २ ८४॥

॥ हरिः ॐ॥ म० १॥ दृशानो रुक्म उर्व्या व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः॥ अ

॥१६॥

ग्निरमृतो अभवद्वयोभिर्यदेनं द्यौरजनयत्सुरेताः॥१॥ नक्तोषासा समनसा
विरूपे धापयेते शिशुमेकं समीची। द्यावाक्षामा रुक्मो अंतर्विभाति देवा
अग्निं धारयन्द्रविणोदाः॥२॥ विश्वा रूपाणि प्रति मुंचते कविः प्रासावीद्भद्रं
द्विपदे चतुष्पदे। वि नाकमख्यत्सविता वरेण्योनु प्रयाणमुषसो विराजति॥३॥
सुपर्णोसि गरुत्मांस्त्रिवृत्ते शिरः। गायत्रं चक्षुर्बृहद्रथंतरे पक्षौ॥ स्तो
म आत्मा छंदांस्यंगानि यजूंषि नाम। साम ते तनूर्वामदेव्यं यज्ञायज्ञि
यं पुच्छं धिष्ण्याः शफाः॥ सुपर्णोसि गरुत्मान्दिवं गच्छ स्वः पत॥ विष्णोः
क्रमोसि सपत्नहा गायत्रं छंद आरोह। पृथिवीमनु विक्रमस्व॥ विष्णोः

॥१६॥

क्रमोस्यभिमातिहा त्रैष्टुभं छंद आरोह॥ अंतरिक्षमनु विक्रमस्व॥ विष्णोः
क्रमोस्यरातीयतो हंता जागतं छंद आरोह॥ दिवमनु विक्रमस्व॥ विष्णोः क्रमोसि
शत्रूयतो हंतानुष्टुभं छंद आरोह॥ दिशोनु विक्रमस्व॥५॥ अक्रंददग्निः स्तन

१८

यन्निव द्यौः क्षामा रेरिहद्वीरुधः समंजन्। सद्यो जज्ञानो वि हीमिद्धो अख्यदा रो
दसी भानुना भात्यंतः॥६॥ अग्नेभ्यावर्तिन्नभि मा नि वर्तस्वायुषा वर्चसा प्रजया
धनेन॥ सन्या मेधया रय्या पोषेण॥७॥ अग्ने अंगिरः शतं ते संत्वावृतः सहस्रं त
उपावृतः॥ अधा पोषस्य पोषेण पुनर्नो नष्टमा कृधि पुनर्नो रयिमा कृधि॥
॥८॥ पुनरूर्जा नि वर्तस्व पुनरग्न इषायुषा॥ पुनर्नः पाह्यंहसः॥९॥ सह र
य्या नि वर्तस्वाग्ने पिन्वस्व धारया॥ विश्वप्स्न्या विश्वतस्परि॥१०॥ आ त्वाहार्ष

११८॥

मिद्धो अरब्युक्त रोदसी भानुना भात्यंतः ॥२२॥ श्रीणामुदारो धरुणो रयीणां
मनीषाणां प्रार्पणः सोमगोपाः ॥ वसुः सूनुः सहसो अप्सु राजा विभात्यग्र
उषसामिधानः ॥२३॥ विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमा
नः ॥ वीळुं चिदद्रिमभिनत्परायं जना यदग्निमयजंत पंच ॥२४॥ उशिक्पा
वको अरतिः सुमेधा मर्त्येष्वग्निरमृतो नि धायि ॥ इयर्ति धूममरुषं भरिभ्र
णं दुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥२५॥ दृशानो रुक्म उर्व्या व्यद्यौद्दुर्मर्षमायुः
श्रिये रुचानः ॥ अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥२६॥
यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवंतमग्ने ॥ प्र तं नय प्रतरं वस्यो

॥११८॥

अच्छा ॥ निसुम्नं देववीतं यविष्ठ ॥२७॥ आ तं भज सौश्रवसेष्वग्न उक्थ आ भज
शस्यमाने ॥ प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥२८॥
त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि ॥ त्वया सह द्रविण
मिच्छमाना व्रजं गोमंतमुशिजो विवव्रुः ॥२९॥ अस्ताव्यग्निर्नराꣳ सुशेवो
वैश्वानर ऋषिभिः सोमगोपाः ॥ अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयि
मस्मे सुवीरं ॥ ॥ॐ॥ समिध्याग्निं दुवस्यत घृतैर्बोधयतातिथिं ॥ आस्मि
न्हव्या जुहोतन ॥१॥ उदु त्या विश्वे देवा अग्ने भरंतु चित्तिभिः ॥ स नो
भव शिवस्त्वं सुप्रतीको विभावसुः ॥३॥ प्रेदग्ने ज्योतिष्मान्याहि शिवेभि

उक्थ

रर्चिभिष्ट्वम्॥ बृहद्भिर्भानुभिर्भासन्माहिंसीस्तन्वा प्रजाः॥३॥ अक्रन्ददग्नि
स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन्॥ सद्यो जज्ञानो वि हीमिद्धो अख्य
दा रोदसी भानुना भात्यन्तः॥४॥ प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न
रोचते बृहद्भाः॥ अभि यः पूरुं पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः॥५
॥५॥ आपो देवीः प्रतिगृह्णीत भस्मैतत्स्योने कृणुध्वं सुरभा उ लोके॥ तस्मै
नमन्तां जनयः सुपत्नीर्मातेव पुत्रं बिभृताप्स्वेनत्॥६॥ अप्स्वग्ने सधिष्टव सौष
रु३ धीरनु रुध्यसे॥ गर्भे सञ्जायसे पुनः॥७॥ गर्भो अस्योषधीनां गर्भो वनस्पतीनां॥
गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि॥८॥ प्रसद्य भस्मना योनिमपश्च
पृथिवीमग्ने॥ संसृज्य मातृभिष्ट्वं ज्योतिष्मान्पुनरासदः॥९॥ पुनरासद्य सदन

५१२

मपश्च पृथिवीमग्ने॥ शेषे मातुर्यथोपस्थेऽन्तरस्यां शिवतमः॥१०॥ पुनरूर्जा निवर्तस्व
पुनरग्न इषायुषा॥ पुनर्नः पाह्यंहसः॥११॥ सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया॥ विश्व
प्स्न्या विश्वतस्परि॥१२॥ बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्व
धावः॥ पीयति त्वो अनु त्वो गृणाति वन्दारुष्टे तन्वं वन्दे अग्ने॥१३॥ स बोधि सूरि
दा५ र्मघवा वसुपते वसु[illegible]वन्॥ युयोध्यस्मद्द्वेषांसि विश्वकर्मणे स्वाहा॥१४॥ पुनस्त्वा
दित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः॥ घृतेन त्वं तन्वं वर्धयस्व
सत्याः सन्तु यजमानस्य कामाः स्वाहा॥१५॥ ॥४१॥ अपेत वीत वि च सर्पतातो येऽत्र स्थ
पुराणा ये च नूतनाः॥ अदाद्यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै॥
संज्ञानमसि कामधरणं मयि ते कामधरणं भूयात्॥ अग्नेर्भस्मास्यग्नेः पुरीषम

सि॥ चित स्थ परिचित ऊर्ध्वचितः श्रयध्वम्॥४६॥ अयꣳ सो अग्निर्यस्मिन्त्सोममिंद्रः सुतं दधे जठरे वावशानः॥ सहस्रियं वाजमत्यं न सप्तिꣳ ससवान्त्सन्त्स्तूयसे जातवेदः॥४७॥ अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र॥ येनांतरिक्षमुर्वाततंथ त्वेषः स भानुरर्णवो नृचक्षाः॥४८॥ अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऽ ऊचिषे धिष्ण्या ये॥ या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठंत आपः॥४९॥ पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः॥ जुषंतां यज्ञमद्रुहोनमीवा ऽ इषो महीः॥५०॥ इडामग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साधा॥ स्यान्नः सूनुस्तनयो विजावाग्ने

सा ते सुमतिर्भूत्वस्मे॥५१॥ अयं ते योनिर्ऋत्वियो यतो जातो ऽ अरोचथाः॥ तं जानन्नग्न आरोहाथा नो वर्द्धया रयिम्॥५२॥ चिदसि तया देवतयांगिरस्वद्ध्रुवा सीद [illegible] दप परिचिदसि तया देवतयांगिरस्वद्ध्रुवा सीद॥५३॥ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम्॥ इंद्राग्नी त्वा बृहस्पतिरस्मिन्योना ऽ असीषदन्॥५४॥ ता अस्य सूददोहसः सोमꣳ श्रीणंति पृश्नयः॥ जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः॥५५॥ इंद्रं विश्वा ऽ अवीवृधन्त्समुद्रव्यचसं गिरः॥ रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम्॥५६॥ समितꣳ संकल्पेथाꣳ संप्रियौ रोचिष्णू सुमनस्यमानौ॥ इषमूर्ज्जमभि संवसानौ॥५७॥ संवां मनाꣳसि संव्रता

√सी

समुचिता न्याकृरम्॥ अग्नेपुरीष्याधिपाभवत्वन्न ईषमूर्जंयजमानायधेहि॥
॥५६॥ अग्नेत्वंपुरीष्योरयिमान्पुष्टिमाँ२ऽअसि। शिवाःकृत्वा दिशः सर्वाः
स्वंयोनिमिहासदः॥५७॥ भवतन्नः समनसौ सचेतसावरेपसौ॥ माय
ज्ञ२ हिंसिष्टमायज्ञपतिंजातवेदसौ शिवौभवतमद्यनः॥५८॥ मातेव पु
त्रं पृथिवी पुरीष्यमग्निं२स्वेयोनावभारुखा॥ तांविश्वैर्देवैर्ऋतुभिः
संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चतु॥६०॥ असुन्वन्तमयजमान
मिच्छस्तेनस्येत्यामन्विहितस्करस्य॥ अन्यमस्मदिच्छसातइत्यानमोदे
वीनिर्ऋते तुभ्यमस्तु॥ नमः सुतेनिर्ऋतेतिग्मतेजोयस्मयंविचृता बं

+पु५

धमेतम्॥ यमेनत्वंयम्यासंविदानोत्तमेनाकेअधिरोहयैनम्॥६२॥ यस्या
स्तेघोरआसंजुहोम्येषांबंधनामवसर्जना या॥ यांत्वाजनोभूमिरितिप्रमं
दते निर्ऋतिंत्वाहंपरिवेदविश्वतः॥६३॥ यंते देवीनिर्ऋतिराबबंधपाशं
ग्रीवास्वविचृत्यम्॥ तंते विष्याम्यायुषोनमध्यादथैतंपितुमद्धिप्रसूतः॥
नमोभूत्यैयेदंचकार॥६४॥ निवेशनः संगमनोवसूनांविश्वारूपाभिचष्टे शची
भिः॥ देवइवसवितासत्यधर्मेन्द्रोनतस्थौसमरेपथीनाम्॥६६॥ सीरापु
ञ्जतिकवयोयुगावितन्वतेपृथक्॥ धीरादेवेषुसुम्नया॥६७॥ युनक्तसीरा
वियुगातनुध्वंकृतेयोनौवपतेहबीजम्॥ गिराचश्रुष्टिः सभराअसन्नो॥

२४

नेदीयइत्सृण्यःपक्वमेयात्॥२४॥ शुनंसुफालाविकृषंतुभूमिं
शुनंकीनाशाअभियंतुवाहैः॥ शुनासीराहविषातोशमाना
सुपिप्पलाओषधीःकर्त्तमस्मे॥२५॥ घृतेनसीतामधुनासमज्य
तांविश्वैर्देवैरनुमतामरुद्भिः॥ ऊर्जस्वतीपयसापिन्वमा
नास्मान्सीतेपयसाभ्याववृत्स्व॥२६॥ लांगलंपवीरवत्सुशेवं
सोमपित्सरु।तदुद्वपतिगामविंप्रफर्व्यं चपीवरींप्रस्थावद्रथवाह
नम्॥२७॥ कामंकामदुघेधुक्ष्वमित्रायवरुणायच।इंद्रायाश्विभ्यांपूष्णेप्र

२०

जाभ्यऽओषधीभ्यः॥२८॥ विमुच्यध्वमघ्न्यादेवयाना॥ अगन्मतमसस्पारमस्य॥ ज्यो
तिरापाम॥२९॥ सजूरब्दोअयवोभिःसजूरुषाअरुणीभिः॥ सजोषसाअश्विनाद
ंसोभिःसजूःसूरएतशेनसजूर्वैश्वानरइडयाघृतेनस्वाहा॥३०॥ याओष
धीःपूर्वाजातादेवेभ्यस्त्रियुगंपुरा॥ मनैनुबभ्रूणामहंशतंधामानिसप्तच ॥३१॥
शतंवोअंबधामानिसहस्रमुतवोरुहः॥ अधाशतक्रत्वोयूयमिमंमेऽअगदंकृ
त॥३२॥ ओषधीःप्रतिमोदध्वंपुष्पवतीःप्रसूवरीः॥ अश्वाऽइवसजित्वरीर्वीरुधः
पारयिष्ण्वः॥३३॥ ओषधीरितिमातरस्तद्वोदेवीरुपब्रुवे॥ सनेयमश्वंगांवास
आत्मानंतवपूरुषा॥३४॥ अश्वत्थेवोनिषदनंपर्णेवोवसतिष्कृता॥ गो
भाजइत्किलासथयत्सनवथपूरुषम्॥३५॥ यत्रौषधीःसमग्मतराजानःस

मिताइव॥ विप्रःसउच्यतेभिषग्रक्षोहामीवचातनः॥२६॥ अश्वावतीं सोमावतीमूर्जयंतीमुदोजसं॥ आविसिसर्वा ॐषधीरस्मा अरिष्टतातये॥२७॥ उच्छुष्मा ॐषधीनांगावोगोष्ठादिवेरते॥ धनंसनिष्यंतीनामात्मानंतव पूरुष॥२८॥ इष्कृतिर्नामवोमाताथोयूयंस्थनिष्कृतीः॥ सीराःपतत्रिणीस्थनयदामयतिनिष्कृथ॥२९॥ अतिविश्वाःपरिष्ठास्तेनइववज्रमक्रमुः॥ ॐषधीःप्राचुच्यवुर्यत्किंचतन्वोरपः॥३०॥ यदिमावाजयन्नहमोषधीर्हस्तआदधे॥ आत्मायक्ष्मस्यनश्यतिपुराजीवगृभोयथा॥३१॥ यस्यौषधीःप्रसर्पथांगमंगंपरुःपरुः॥ ततोयक्ष्मंविबाधध्वउग्रोमध्यमशी

रिव॥३२॥ साकंयक्ष्मप्रपतचाषेणकिकिदीविना॥ साकंवातस्यध्राज्या साकंनश्यनिहाकया॥३३॥ अन्यावोअन्यामवत्वन्यान्यस्याउपावत॥ ताः सर्वाःसंविदानाइदंमेप्रावतावचः॥३४॥ याःफलिनीर्याअफलाअपुष्पा याश्चपुष्पिणीः॥ बृहस्पतिप्रसूतास्तानोमुंचंत्वंहसः॥३५॥ मुंचंतुमा शपथ्यादथोवरुण्यादुत॥ अथोयमस्यपड्बीशात्सर्वस्माद्देवकिल्बिषात्॥ ॥३६॥ अवपतंतीरवदंदिवॐषधयस्परि॥ यंजीवमश्नवामहैनसरिष्याति पूरुषः॥३७॥ याॐषधीःसोमराज्ञीर्बह्वीःशतविचक्षणाः॥ तासांत्व मस्युत्तमारंकामायशंहृदे॥३८॥ याॐषधीःसोमराज्ञीर्विष्ठिताःपृ

पृथिवीमनु । बृहस्पतिप्रसूता अस्यै संदत्त वीर्यं ॥९४॥ याश्चेदमुपशृण्वंति याश्च दूरं परागताः ॥ सर्वाः संगत्य वीरुधो ऽस्यै संदत्त वीर्यम् ॥९५॥ नाशयित्री बलासस्यार्शस उपचितामसि ॥ अथो शतस्य यक्ष्माणां पाकारोरसि नाशनी ॥९६॥ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः ॥ त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥९८॥ …

(As written on the page:)

पिवीमनु । बृहस्पतिप्रसूता अस्यै संदत्तवीर्यं ॥९४॥ याश्चेदमुपशृण्वंति याश्च
दूरं परागताः ॥ सर्वाः संगत्य वीरुधो ऽस्यै संदत्तवीर्यम् ॥९५॥ नाशयित्री बलास
स्यार्शस उपचितामसि ॥ अथो शतस्य यक्ष्माणां पाकारोरसि नाशनी ॥९६॥
त्वा वो रिषत्खनिता यस्मै चाहं खनामि वः ॥ द्विपच्चतुष्पदस्माकं सर्वमस्त्व
नातुरम् ॥९७॥ ॐ षधयः संवदंते सोमेन सह राज्ञा ॥ यस्मै कृणोति ब्राह्मण
स्तं राजन्पारयामसि ॥९८॥ त्वां गंधर्वा अखनँस्त्वामिंद्रस्त्वां बृहस्प
तिः ॥ त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत ॥१००॥ सहस्व मे अरातीः सहस्व पृतनायतः ॥ सहस्व सर्वं पाप्मानं सहमानास्योषधे ॥
तवक्ष्ता उपस्तयः ॥ उपस्तिरस्तु सोस्माकं यो अस्माँ अभिदासति ॥१०१॥ मामा

रोग व्या०

हिंसीज्जनिता यः पृथिव्या यो वा दिवँ सत्यधर्मा व्यानट् ॥ यश्चापश्चंद्राः प्रथ
मो जजान कस्मै देवाय हविषा विधेम ॥१०२॥ अभ्यावर्तस्व पृथिवी यज्ञेन पयसा
सह ॥ वपां ते अग्निरिषितो अरोहत् ॥१०३॥ अग्ने यत्ते शुक्रं यच्चंद्रं यत्पूतं यच्च
यज्ञियम् ॥ तद्देवेभ्यो भरामसि ॥१०४॥ इषमूर्जमहमित आदमृतस्य यो
निं महिषस्य धाराम् ॥ आ मा गोषु विशत्वा तनूषु जहामि सेदिमनिराममी
वाम् ॥१०५॥ अग्ने तव श्रवो वयो महि भ्राजंते अर्चयो विभावसो ॥ बृहद्भानो
शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥१०६॥ पावकवर्चाः शुक्रवर्चा अनून
वर्चा उदियर्षि भानुना ॥ पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥१०७॥

ऊर्ज्जो नपाज्जातवेदः सुशस्तिभिर्म्मन्दस्व धीतिभिर्हितः ॥ त्वे इषः संदधुर्भूरिवर्प
सश्चित्रोतयो वामजाताः ॥१०८॥ इरज्यन्नग्ने प्रथयस्व जंतुभिरस्मे रायो अम
र्त्य ॥ स दर्शतस्य वपुषो विराजसि पृणक्षि सानसिं क्रतुम् ॥१०९॥ इष्कर्त्तारमध्वरस्य
प्रचेतसं क्षयंतं राधसो महः ॥ रातिं वामस्य सुभगां महीमिषं दधासि सानसिं
रयिम् ॥११०॥ ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो
जनाः ॥ श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥१११॥ आप्या
यस्व समेतु ते विश्वतः सोम वृष्ण्यम् ॥ भवा वाजस्य संगथे ॥११२॥ संते पयांसि
समु यंतु वाजाः संवृष्ण्यान्यभिमातिषाहः ॥ आप्यायमानो अमृताय सो
म दिवि श्रवांस्युत्तमानि धिष्व ॥११३॥ आप्यायस्व मदिंतम सोम विश्वेभिरं
शुभिः ॥ भवा नः सप्रथस्तमः सखा वृधे ॥११४॥ आ ते वत्सो मनो यमत्परमाच्चि
त्सधस्थात् ॥ अग्ने त्वां कामया गिरा ॥११५॥ तुभ्यं ता अंगिरस्तम विश्वाः सुक्षि
तयः पृथक् ॥ अग्ने कामाय येमिरे ॥११६॥ अग्निः प्रियेषु धामसु कामो भूतस्य
भव्यस्य ॥ सम्राडेको विराजति ॥११७॥ ॥१२॥ इति संहितापाठे त्रयोदशोध्या
यः ॥ १३ ॥ हरिः ॐ ॥ मयि गृह्णाम्यग्रे अग्निं रायस्पोषाय सुप्रजास्त्वाय
सुवीर्याय ॥ मामु देवताः सचंताम् ॥१॥ अपां पृष्ठमसि योनिरग्नेः भितः समुद्र
पिन्वमानम् ॥ वर्द्धमानो महाँ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥२॥

स्तजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः॥ स बुध्न्या उपमा अस्य वि
ष्ठाः सतश्च योनिमसतश्च विवः॥३॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य
जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय ह
विषा विधेम॥४॥ द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च
पूर्वः॥ समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः॥५॥ नमो
स्तु सर्पेभ्यो ये के च पृथिवीमनु॥ ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो
नमः॥६॥ या इषवो यातुधानानां ये वा वनस्पतीँरनु॥ ये वावटे
षु शेरते तेभ्यः सर्पेभ्यो नमः॥७॥ ये वामी रोचने दिवो ये वा सूर्यस्य

रश्मिषु॥ येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः॥८॥ कृणुष्व पाजः प्रसितिं न पृ
थ्वीं याहि राजेवामवाँ इभेन॥ तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य र
क्षसस्तपिष्ठैः॥९॥ तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः॥ तपूँष्य
ग्ने जुह्वा पतङ्गानसंदितो विसृज विष्वगुल्काः॥१०॥ प्रतिस्पशो विसृज तूर्णितमो भ
वा पायुर्विशो अस्या अदब्धः॥ यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथि
रादधर्षीत्॥११॥ उदग्ने तिष्ठ प्रत्यातनुष्व न्यमित्राँ ओषतात्तिग्महेते॥ यो नो
अरातिँ समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम्॥१२॥ ऊर्ध्वो भव प्रति विध्या
ध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने॥ अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र

मूर्ध्ना हिरण्मयेन ॥ ३ ॥ अग्नेष्ट्वा तेजसा सादयामि ॥ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृ

ठू २ थिव्या अयम् ॥ अपां रेतांसि जिन्वति ॥ इंद्रस्य त्वौजसा सादयामि ॥ ५ ॥

भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ॥ दिवि मूर्द्धा

नं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥ ६ ॥ ध्रुवासि धरुणास्तृता

विश्वकर्मणा ॥ मा त्वा समुद्र उद्वधीन्मा सुपर्णोऽव्यथमाना पृथिवीं दृंह ॥ ७ ॥

द्रू २ प्रजापतिष्ट्वा सादयत्वपां पृष्ठे समुद्रस्येमन् ॥ व्यचस्वतीं प्रथस्वतीं प्रथस्व पृ

थिव्यसि ॥ ८ ॥ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य

धर्त्री ॥ पृथिवीं यच्छ पृथिवीं दृंह पृथिवीं मा हिंसीः ॥ ९ ॥ विश्वस्मै

प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ॥ अग्निष्ट्वाभि पातु मह्या स्व

स्त्या छर्दिषा शंतमेन तया देवतयांगिरस्वद्ध्रुवा सीद ॥ १० ॥ काण्डात्काण्डात्प्ररोहं

ती परुषः परुषस्परि ॥ एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥ ११ ॥ या शतेन प्र

तनोषि सहस्रेण विरोहसि ॥ तस्यास्ते देवीष्टके विधेम हविषा वयम् ॥ १२ ॥

यास्ते अग्ने सूर्ये रुचो दिवमातन्वंति रश्मिभिः ॥ ताभिर्नो अद्य सर्वा

भी रुचे जनाय नस्कृधि ॥ १३ ॥ या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः ॥ इंद्राग्नी

ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥ १४ ॥ विराड् ज्योतिरधारयत्स्वराड्ज्यो

तिरधारयत् ॥ प्रजापतिष्ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् ॥ विश्वस्मै

श्चेस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर्यच्छ ॥ अग्निष्टेऽधिपतिस्तया देवत
यांगिरस्वद्ध्रुवा सीद ॥२४॥ मधुश्च माधवश्च वासंतिकाऽऋतू अग्नेरं
तः श्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पंतामापऽओषधयः कल्पंतामग्
नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः ॥ येऽअग्नयः समनसोंऽतरा द्यावा
पृथिवीऽइमे ॥ वासंतिकाऽऋतूऽअभिकल्पमानाऽइंद्रमिव देवाऽअभि
संविशंतु तया देवतयांगिरस्वद्ध्रुवे सीदतं ॥२५॥ अषाढासि सह
माना सहस्वारातीः सहस्व पृतनायतः ॥ सहस्रवीर्यासि सा मा जिन्व ॥२६॥ मा
सहस्व मा । अभिमातीः सहस्व पृतनायतः ॥ सहस्व सर्वां पाप्मानं सहमानास्यो न

षधे ॥२७॥ मधु वाता ऋतायते मधु क्षरंति सिंधवः ॥ माध्वीर्नः संत्वोषधीः
॥२८॥ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ॥ मधु द्यौरस्तु नः पिता ॥२९॥
मधुमान्नो वनस्पतिर्मधुमाँऽअस्तु सूर्यः ॥ माध्वीर्गावो भवंतु नः ॥३०॥
अपां गम्भन्त्सीद मा त्वा सूर्योऽभिताप्सीन्माग्निर्वैश्वानरः ॥ अच्छिन्नपत्राः प्र
जाऽअनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम् ॥३१॥ त्रीन्त्समुद्रान्त्समसृपत्स्व
र्गानपां पतिर्वृषभऽइष्टकानाम् ॥ पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ
यत्र पूर्वे परेताः ॥३२॥ मही द्यौः पृथिवी च नऽइमं यज्ञं मिमिक्षतां ॥ पिपृ
तान्नो भरीमभिः ॥३३॥ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ॥ इंद्र

स्पृशुज्यः सर्वा ॥ ३४॥ ध्रुवासि धरुणेतो जज्ञे प्रथममेभ्यो योनिभ्यो ऽअधि
जातवेदाः ॥ स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन् ॥ ३ ॥
इषे राये रमस्व सहसे द्युम्न ऊर्जे अपत्याय ॥ सम्राडसि स्वराडसि सा
रस्वतौ त्वोत्सौ प्रावताम् ॥ ३५॥ अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ॥
अरं वहन्ति मन्यवे ॥ ३६॥ युक्ष्वा हि देवहूतमाँ ऽअश्वाँ ऽअग्ने रथीरिव ॥
नि होता पूर्व्यः सदः ॥ ३७॥ सम्यक् स्रवन्ति सरितो न धेना अन्तर्हृदा म
नसा पूयमानाः ॥ घृतस्य धारा ऽअभि चाकशीमि हिरण्ययो वेत
सो मध्ये अग्नेः ॥ ३८॥ ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा ॥ अभूदि
दं विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य च ॥ ४०॥ अग्निर्ज्योति
षा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ॥ सहस्रदा ऽअसि सहस्रा
य त्वा ॥ ४०॥ आदित्यं गर्भं पयसा समङ्धि सहस्रस्य प्रतिमां विश्वरूपम् ॥
परि वृङ्धि हरसा माभि मंस्थाः शतायुषं कृणुहि चीयमानः ॥ ४१॥
वातस्य जूतिं वरुणस्य नाभिमश्वं जज्ञानं सरिरस्य मध्ये ॥ शिशु
न्नदीनां हरिमद्रिबुध्नमग्ने मा हिंसीः परमे व्योमन् ॥ ४३॥ अज
स्रमिन्दुमरुषं भुरण्युमग्निमीडे पूर्वचित्तिं नमोभिः ॥ स पर्वभिर्ऋ
तुशः कल्पमानो गां मा हिंसीरदितिं विराजम् ॥ ४४॥ वरूत्रीं त्वष्टुर्वरु

॥३०॥ त४

णस्य नाभिमविं जज्ञानाꣳ रजसस्परस्मात्॥ महीꣳ साहस्रीमसुर
स्य मायामग्ने मा हिꣳसीः परमे व्योमन्॥४४॥ यो अग्निरग्नेरध्य
जायत शोकात्पृथिव्या उत वा दिवस्परि॥ येन प्रजा विश्वकर्मा जजान
तमग्ने हेडः परि ते वृणक्तु॥४५॥ चित्रं देवानामुदगादनीकं चक्षुर्मि
त्रस्य वरुणस्याग्नेः॥ आप्रा द्यावापृथिवी अंतरिक्षꣳ सूर्य आत्मा जग
तः स्तस्थुषश्च॥४६॥ इमं मा हिꣳसीर्द्विपादं पशुꣳ सहस्राक्षो मेधाय
चीयमानः॥ मयुं पशुं मेधमग्ने जुषस्व तेन चिन्वानः स्तन्वो निषीद॥
मयुं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छतु॥४७॥ इमं मा हिꣳसीरेक ॥३०॥

शफं पशुं कनिक्रदं वाजिनं वाजिनेषु॥ गौरमारण्यमनु ते दिशामि ते
न चिन्वानः स्तन्वो निषीद॥ गौरं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छतु॥
॥४८॥ इमꣳ साहस्रꣳ शतधारमुत्सं व्यच्यमानꣳ सरिरस्य मध्ये॥
घृतं दुहानामदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन्॥ गवयमार
ण्यमनु ते दिशामि तेन चिन्वानः स्तन्वो निषीद॥ गवयं ते शुगृच्छतु यं द्वि
ष्मस्तं ते शुगृच्छतु॥५०॥ इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विप
दां चतुष्पदाम्॥ त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा हिꣳसीः परमे व्यो
मन्॥ उष्ट्रमारण्यमनु ते दिशामि तेन चिन्वानः स्तन्वो निषीद॥ उष्ट्रं

॥३२॥

तस्य मनो वैश्वकर्मणम् ॥ ग्रीष्मो मानसस्त्रिष्टुप् ग्रैष्मी ॥५७॥ त्रिष्टुभः स्वार
ं स्वारादैतयुगीन्तर्यामोन्तर्यामात्पंचदशः पंचदशाद् बृहत् ॥ भरद्वाज ऋषिः प्रजाप
तिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः ॥५८॥ अयं पश्चात् ॥ विश्वव्य
चास्तस्य चक्षुर्वैश्वव्यचसम् ॥ वर्षाश्चाक्षुष्यो जगती वार्षी ॥५९॥ जग
त्या ऋक्सममृक्समाच्छुक्रः शुक्रात्सप्तदशः सप्तदशाद्वैरूपम् ॥ जमद
दग्निर्ऋषिः प्रजापतिगृहीतया त्वया चक्षुर्गृह्णामि प्रजाभ्यः ॥६०॥
इदमुत्तरात्स्वस्तस्य श्रोत्रं सौवम् ॥ शारद्यौत्र्यनुष्टुप् शारदी ॥६१॥
अनुष्टुभ ऐडमैडान्मन्थी मन्थिन एकविंश एकविंशाद्

॥३२॥

वैराजम् ॥ विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णा
मि प्रजाभ्यः ॥६२॥ इयमुपरि मतिः सस्यै वाङ्मती या ॥ हैमन्तो वाच्यः
पङ्क्तिर्हैमन्ती ॥६३॥ पङ्क्त्यै निधनवन्निधनवत आग्रयणः
आग्रयणात्त्रिणवत्रयस्त्रिंशौ त्रिणवत्रयस्त्रिंशाभ्यां
शाक्वररैवते ॥ विश्वकर्म ऋषिः प्रजापतिगृहीतया त्वया वाचं
गृह्णामि प्रजाभ्यः ॥ लोकं पृण ता अस्य सूददोहसः ॥६४॥ [illegible]
मसोनुवाकेषु चतुर्दशोध्यायः ॥ पंचषष्ठि [illegible] मनुगौरंगवपडृष्ठे [illegible]

॥श्री॥ हरिः ॐ ॥ ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि ध्रुवं योनिमासीद सा
धुया ॥ उख्यस्य केतुं प्रथमं जुषाणा ॥ अश्विनाध्वर्यू सादयतामिह त्वा ॥
१ ॥ कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः ॥ अ
भि त्वा रुद्रा वसवो गृणंत्विमा ब्रह्म पीपिहि सौभगायाश्विनाध्वर्यू
सादयतामिह त्वा ॥ २ ॥ स्वैर्दक्षैर्दक्षपितेह सीद देवानां सुम्ने बृ
हते रणाय ॥ पितेवैधि सूनव आ सुशेवा स्वावेशा तन्वा संवि
शस्वाश्विनाध्वर्यू सादयतामिह त्वा ॥ ३ ॥ पृथिव्याः पुरीषमस्य
प्सो नाम तां त्वा विश्वे अभिगृणंतु देवाः ॥ स्तोमपृष्ठा घृतवती

ह सीद प्रजावदस्मे द्रविणायजस्वाश्विनाध्वर्यू सादयतामिह त्वा ॥ ४ ॥ अ
दित्यास्त्वा पृष्ठे सादयाम्यंतरिक्षस्य धर्त्री विष्टंभनी दिशामधिपत्नी भुवना
नां ॥ ऊर्मिर्द्रप्सो अपामसि विश्वकर्मा त ऋषिरश्विनाध्वर्यू सादयतामिह
त्वा ॥ ५ ॥ शुक्रश्च शुचिश्च ग्रैष्मावृतू अग्नेरंतः श्लेषोसि ॥ कल्पेतां द्यावा
पृथिवी कल्पंतामाप ओषधयः कल्पंतामग्नयः पृथङ्मम ज्यैष्ठ्या
य सव्रताः ॥ ये अग्नयः समनसोंतरा द्यावापृथिवी इमे ॥ ग्रैष्मावृतू अ
भिकल्पमाना इंद्रमिव देवा अभिसंविशंतु तया देवतयांगिरस्वद्ध्रु
वे सीदतम् ॥ ६ ॥ सजूरृतुभिः सजूर्विधाभिः सजूर्देवैः

६१

॥३४॥

सजूर्देवैर्वयोनाधैः॥ अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा॥
सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः सजूर्देवैर्वयोनाधैः॥ अग्न
ये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा॥ सजूरृतुभिः सजूर्वि
धाभिः सजू रुद्रैः सजूर्देवैर्वयोनाधैः॥ अग्नये त्वा वैश्वानरायाश्विना
ध्वर्यू सादयतामिह त्वा॥ सजूरृतुभिः सजूर्विधाभिः सजूरादित्यैः
सजूर्देवैर्वयोनाधैः॥ अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा॥
सजूरृतुभिः सजूर्विधाभिः सजूर्विश्वैर्देवैः सजूर्देवैर्वयोनाधैः॥ अग्नये
त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा॥७॥ प्राणं मे पाह्यपानं मे

॥३४॥

पाहि व्यानं मे पाहि॥ चक्षुर्म उर्व्या विभाहि श्रोत्रं मे श्लोकय॥ ॥ अपः पिन्वौ
षधीर्जिन्व द्विपादव चतुष्पात्पाहि॥ दिवो वृष्टिमेरय॥८॥ मूर्धा वयः प्रजा
पतिश्छन्दः क्षत्रं वयो मयन्दं छन्दः॥ विष्टम्भो वयोऽधिपतिश्छन्दो विश्वकर्मा वयः
परमेष्ठी छन्दः॥९॥ बस्तो वयो विबलं छन्दो वृष्णिर्वयो विशालं छन्दः॥ पुरुषो वयस्
तन्द्रं छन्दो व्याघ्रो वयोऽनाधृष्टं छन्दः॥१०॥ सिꣳहो वयश्छदिश्छन्दः पष्ठवाड्
वयो बृहती छन्दः॥ उक्षा वयः ककुप्छन्द ऋषभो वयः सतोबृहती छन्दः॥११॥ अ
नड्वान्वयः पङ्क्तिश्छन्दो धेनुर्वयो जगती छन्दः॥ त्र्यविर्वयस्त्रिष्टुप्छन्दो दित्य
वाड्वयो विराट्छन्दः॥१२॥ पञ्चाविर्वयो गायत्री छन्दस्त्रिवत्सो वय उष्णिक्छन्दः॥

तुर्यवाड्वयोनुष्टुप्छंदो लोकंपृणा ता अस्येंदुं विश्वाः ॥१३॥ ध्या ॥ इंद्राग्नी अ
व्यथमानामिष्टकां दृꣳहतं युवं ॥ पृष्ठेन द्यावापृथिवी अंतरिक्षं च विबा
धसे ॥१४॥ विश्वकर्मा त्वा सादयत्वंतरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीं ॥
अंतरिक्षं यच्छांतरिक्षं दृꣳहांतरिक्षं मा हिꣳसीः ॥ विश्वस्मै प्राणाया
पानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ॥ वायुष्ट्वाभिपातु मह्या स्वस्त्या छ
र्दिषा शंतमेन तया देवतयांगिरस्वद्ध्रुवा सीद ॥१५॥ राज्ञ्यसि प्राची दिग्विराळ
सि दक्षिणा दिक्सम्राळसि प्रतीची दिक्स्वराळस्युदीची दिगधिपत्न्यसि
बृहती दिक् ॥ विश्वकर्मा त्वा सादयत्वंतरिक्षस्य पृष्ठे ज्योतिष्मतीं ॥ विश्वस्मै

५०

प्राणायापानाय व्यानाय विश्वं ज्योतिर्यच्छ ॥ वायुष्टेधिपतिस्तया देवतयांगि
रस्वद्ध्रुवा सीद ॥ नभश्च नभस्यश्च वार्षिकावृतू अग्नेरंतःश्लेषोसि ॥ क
ल्पेतां द्यावापृथिवी कल्पंतामाप ओषधयः कल्पंतामग्नयः पृथङ्म
मज्यैष्ठ्याय सव्रताः ॥ ये अग्नयः समनसोंतरा द्यावापृथिवीऽइमे ॥ वार्षिका
ऋतू अभिकल्पमाना इंद्रमिव देवा अभिसंविशंतु तया देवतयांगिरस्व
द्ध्रुवे सीदतं ॥ इषश्चोर्जश्च शारदाऽऋतू अग्नेरंतःश्लेषोसि ॥ कल्पेतां
द्यावापृथिवी कल्पंतामापऽओषधयः कल्पंतामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्र
ताः ॥ येऽअग्नयः समनसोंतरा द्यावापृथिवीऽइमे ॥ शारदाऽऋतू अभि

॥३६॥

कल्पमानाः इंद्रमिव देवा अभिसंविशंतु तया देवतयांगिरस्वद्ध्रुवे सीदतम् ॥१६॥ आयुर्मे पाहि प्राणं मे पाह्यपानं मे पाहि व्यानं मे पाहि चक्षुर्मे पाहि श्रोत्रं मे पाहि वाचं मे पिन्व मनो मे जिन्वात्मानं मे पाहि ज्योतिर्मे यच्छ ॥१७॥ मा छंदः प्रमा छंदः प्रतिमा छंदो अस्रीवयः छंदः पंक्तिः छंद उष्णिक् छंदः ॥ बृहती छंदो नुष्टुप् छंदो विराट् छंदो गायत्री छंदः त्रिष्टुप् छंदो जगती छंदः ॥१८॥ पृथिवी छंदोंतरिक्षं छंदो द्यौः छंदः समाः छंदः ॥ नक्षत्राणि छंदो वाक् छंदो मनः छंदः ॥२०॥ मनः छंदः कृषिः छंदो गौः छंदः ॥ अजा छंदो श्वः छंदः ॥२९॥ अग्निर्देवता वातो देवता सूर्यो देवता चंद्रमा देवता ॥ वसवो देवता रुद्रा देवता ॥ आदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवता ॥ इंद्रो देवता वरुणो देवता ॥२०॥ मूर्द्धासि राड् ध्रुवासि धरुणा

॥३६॥

वर्चो द्वाविंशः ॥

धर्त्र्यसि धरणी ॥ आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा ॥२१॥ यंत्री राड् यंत्र्यसि यमनी ध्रुवासि धरित्री ॥ इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ॥ लोकं ता इंद्रं ॥ अस्य इंदुविश्वा ॥ ॥२२॥ आशुस्त्रिवृद्भांतः पंचदशो व्योमा सप्तदशो धरुण एकविंशः प्रतूर्तिरष्टादशः ॥ तपो नवदशोभीवर्तः सविंशो संभरणस्त्रयोविंशो योनिश्चतुर्विंशः ॥२३॥ गर्भाः पंचविंश ओजस्त्रिणवः क्रतुरेकत्रिंशः प्रतिष्ठा त्रयस्त्रिंशो ब्रध्नस्य विष्टपं चतुस्त्रिंशः ॥ नाकः षट्त्रिंशो विवर्तोष्टाचत्वारिंशो धर्त्रं चतुष्टोमः ॥२४॥ अग्नेर्भागोसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत्स्तोमः ॥ इंद्रस्य भागोसि विष्णोराधिपत्यं क्षत्रं स्पृतं पंचदश स्तो

मः॥२७॥ नृचक्षसां भागोसि धातुराधिपत्यं जनित्रं स्पृतं सप्तदश स्तोमः॥ मि
त्रस्य भागोसि वरुणस्याधिपत्यं दिवो वृष्टिर्वात स्पृत एकविंश स्तोमः॥२८॥
वसूनां भागोसि रुद्राणामाधिपत्यं चतुष्पात् स्पृतं चतुर्विंश स्तोमः॥ आदि
त्यानां भागोसि मरुतामाधिपत्यं गर्भाः स्पृताः पंचविंश स्तोमः॥२९॥ अदितै
धि ५ भागोसि पूष्णऽआधिपत्य मोजः स्पृतं त्रिणव स्तोमः॥ देवस्य सवितुर्भागोसि बृ
हस्पतेराधिपत्यं समीचीर्दिशः स्पृताश्चतुष्टोम स्तोमः॥३०॥ यवानां
भागोस्ययवानामाधिपत्यं प्रजाः स्पृताश्चतुश्चत्वारिंश स्तोमः॥ ऋभू
णां भागोसि विश्वेषां देवानामाधिपत्यं भूतं स्पृतं त्रयस्त्रिंश स्तोमः॥

सहश्च सहस्यश्च हैमंतिकावृतू अग्नेरंतः श्लेषोसि॥ कल्पेतां द्यावापृथिवी क
ल्पंतामापऽओषधयः कल्पंतामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः॥ येऽअ
ग्नयः समनसोंतरा द्यावापृथिवीऽइमे हैमंतिकावृतू अभिकल्पमानाऽ
इंद्रमिव देवाऽअभिसंविशंतु तया देवतयांगिरस्वद्ध्रुवे सीदतं॥२७॥
एकयास्तुवत प्रजाऽअधीयंत प्रजापतिरधिपतिरासीत् तिसृभिरस्तुवत ब्रह्मा
सृज्यत ब्रह्मणस्पतिरधिपतिरासीत्॥ पंचभिरस्तुवत भूतान्यसृज्यं
सूसी २ त भूतानां पतिरधिपतिरासीत् सप्तभिरस्तुवत सप्तऋषयोसृज्यंत धाताधि
पतिरासीत्॥२८॥ नवभिरस्तुवत पितरोसृज्यंतादितिरधिपत्न्यासीदेकाद

॥३६॥

शभिरस्तूवत ऽ ऋतवोसृज्यंता र्तवा ऽ अधिपतय ऽ आसन् ॥ त्रयोदशभिर
स्तूवत मासा अ सृज्यंत संवत्सरोधिपतिरासीत्पंचदशभिरस्तूवत क्षत्रम
सृज्यतेंद्रोधिपतिरासीत् ॥ २३ ॥ सप्तदशभिरस्तूवत ग्राम्याः पश
वोसृंतबृहस्पतिरधिपतिरासीन्नवदशभिरस्तूवत शूद्रार्या अ
सृज्येतामहोरात्रे अधिपत्नी ऽ आस्ताम् ॥ एकविंशत्यास्तूवतैक
शफाः पशवोसृज्यंत वरुणोधिपतिरासीत्त्रयोविंशत्यास्तुवत क्षुद्राः पश
वोसृज्यंत पूषाधिपतिरासीत् ॥ २४ ॥ पंचविंशत्यास्तूवतारण्याः पश
वोसृज्यंत वायुरधिपतिरासीत्सप्तविंशत्यास्तूवत द्यावापृथिवी व्यैतां

ज्यं

स्तूवत ३

॥३८

वसवो रुद्रा ऽ आदित्या ऽ अनुव्यायंस्त एवाधिपतय आसन् ॥ नवविंश
त्यास्तूवत वनस्पतयो सृज्यंत सोमोधिपतिरासीदेकत्रिंशतास्तूवत
प्रजा अ सृज्यंत यवाश्चायवाश्चाधिपतय ऽ आसन् ॥ त्रयस्त्रिंशता
स्तूवत भूतान्यशाम्यन्प्रजापतिः परमेष्ठ्यधिपतिरासीत् ॥ लो
कं पृणता ऽ अस्येदु विश्वोः ॥ २५ ॥ ७४ ॥ ध्रुवक्षितिः पंच ॥ ५ ॥ सजूर्ऋतुभिः
स्तिस्रः ॥ ३ ॥ मूर्द्धा वयः पंच ॥ ५ ॥ इंद्राग्नी तिस्रः ॥ ३ ॥ आयुर्मे षट् ॥ ६ ॥ मूर्द्धासि
द्वे ॥ २ ॥ आशु [illegible] ॥ २ ॥ अग्नेर्भागः पंच ॥ ५ ॥ एकया पतस्रः ॥ ४ ॥ नवानुवाकाः पुनः
पंचत्रिंशतः ॥ ३५ ॥ ७४ ॥

ते २

॥६१॥

हरिः ॐम्॥ अग्ने जातान्प्रणुदा नः सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व॥ अस्मे दीदिहि सुमना अहेडंस्तव स्याम शर्मंस्त्रिवरूथ उद्भौ॥१॥ सहसा जातान्प्रणुदा नः सपत्नान्प्रत्यजातान्नुद जातवेदः॥ अधि नो ब्रूहि सुमनस्यमानो वयं स्याम प्रणुदा नः सपत्नान्॥ षोडशी स्तोम ओजो द्रविणं चतुश्चत्वारिंश स्तोमो वर्चो द्रविणं॥२॥ अग्नेः पुरीषमसि अप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः॥ स्तोमपृष्ठा घृतवती हसीद प्रजावदस्मे द्रविणायजस्व॥३॥ एवश्छन्दो वरिवश्छन्दः शंभूश्छन्दः परिभूश्छन्दः॥ आच्छच्छन्दो मनश्छन्दो व्यचश्छन्दः॥४॥ सिन्धुश्छन्दः [illegible] समुद्रश्छन्दः सरिरं छन्दः॥ ककुप्छन्दस्त्रिककुप्छन्दः काव्यं छन्दो अंकुपं छन्दः॥५॥ अक्षरपंक्तिश्छन्दः पदपंक्तिश्छन्दो विष्टारपंक्तिश्छन्दः क्षुरो भ्राजश्छन्दः॥ आच्छच्छन्दः प्रच्छच्छन्दः संयच्छन्दो वियच्छन्दः॥६॥ बृहच्छन्दो रथंतरं छन्दो निकायश्छन्दो विवधश्छन्दः॥ गिरश्छन्दो भ्राजश्छन्दः संस्तुप् छन्दो ऽनुष्टुप्छन्दः॥७॥ एवश्छन्दो वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दः॥

॥६१॥

॥४०॥

विष्पर्द्धाश्छंदो विशालंछंदश्छदिश्छंदो दूरोहणंछंदः॥
तंद्रंछंदो अंकांकंछंदः॥८॥रश्मिना सत्याय सत्यं जीन्व
प्रेतिना धर्मणा धर्मं जिन्व॥अन्वित्या दिवा दिवं जिन्व
संधिनांतरिक्षेणांतरिक्षं जिन्व॥९॥प्रतिधिना पृथि
व्या पृथिवीं जीन्व विष्टंभेन वृष्ट्या वृष्टिं जिन्व॥
प्रवयान्हाहर्जिन्वानुयारात्र्यारात्रीं जिन्व॥१०॥उशि

॥४०॥

जा वसुभ्यो वसूं जिन्व प्रकेतेनादित्येभ्य आदित्याञ्जिन्व॥
तंतुना रायस्पोषेण रायस्पोषं जिन्व संसर्पेण श्रुताय
श्रुतं जिन्व॥११॥ऐडेनौषधीभिरोषधीर्जिन्वोत्तमेन
तनूभिस्तनूर्जिन्व॥वयोधसाधीतेनाधीतं जिन्वाभि
जिता तेजसा तेजो जिन्व॥१२॥प्रतिपदसि प्रतिपदे
त्वानुपदस्यनुपदे त्वा॥संपदसि संपदे त्वा तेजोसि तेज
से त्वा॥१३॥त्रिवृदसि त्रिवृते त्वा प्रवृदसि प्रवृते त्वा॥

तै १

॥५१॥

विवृदसि विवृते त्वा सवृदसि सवृते त्वा ॥१४॥ आक्रमो
स्याक्रमाय त्वा संक्रमोसि संक्रमाय त्वा ॥ उत्क्रमोस्युत्क्रमा
य त्वोत्क्रांतिरस्युत्क्रांत्यै त्वा ॥ अधिपतिनोर्जोर्जं जिन्व
वृषस्त्रिः क्षत्रायं क्षत्रं जिन्व ॥१५॥ राज्ञ्यसि प्राची दिग्व
सवस्ते देवा अधिपतयः ॥ अग्निर्हेतीनां प्रतिधर्ता ॥१६॥
त्रिवृत्त्वा स्तोमः पृथिव्यां श्रयत्वाज्यमुक्थमव्यथा
यै स्तभ्नातु रथंतरं साम प्रतिष्ठित्या अंतरिक्षे ॥१७॥

॥५१॥

५२

ऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथंतु ॥१८॥
विधर्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे नार
लोके यजमानं च सादयंतु ॥१९॥ विराडसि दक्षिणा दि
ग्रुद्रास्ते देवा अधिपतयः ॥ इंद्रो हेतीनां प्रतिधर्ता ॥१९॥ पंचदश
स्त्वा स्तोमः पृथिव्यां श्रयतु प्रउगमुक्थमव्यथायै स्तभ्ना
तु ॥ बृहत्साम प्रतिष्ठित्या अंतरिक्षे ॥२०॥ ऋषयस्त्वा प्रथ
मजा देवेषु दिवो मात्रया वरिम्णा प्रथंतु ॥ विधर्ता चायम

ति१ धिपतिश्रुतेत्वासर्वैविंसेदेवानानाकस्यपृष्ठेस्वर्गेलोकेयजमा
नंचसादयंतु॥२१॥ संम्राळसिप्रतीचीदिगादित्यास्तेदेवा
अधिपतयः॥ वरुणोहेतीनांप्रतिधर्ता॥२२॥ सप्तदशस्त्वा
स्तोमः पृथिव्यांश्रयतु मरुत्वतीयमुक्थमव्यथायैस्त
॥४२॥ भ्नातु॥ वैरूपंसामप्रतिष्ठित्याअंतरिक्षे॥२३॥ ऋष ॥४२॥
यस्त्वाप्रथमजादेवेषुदिवोमात्रयावरिम्णाप्रथंतु
विधर्ताचायमधिपतिश्रुतेत्वासर्वेसंविदानानाक ॥

पृष्ठेस्वर्गेलोकेयजमानंचसादयंतु॥२४॥ स्वराळु
दीचीदिङ्मरुतस्तेदेवाअधिपतयः॥ सोमोहेतीनांप्र
तिधर्ता॥२५॥ एकविंशस्त्वास्तोमः पृथिव्यांश्रयतु
निष्केवल्यमुक्थमव्यथायैस्तभ्नातु॥ वैराजंसामप्र
तिष्ठित्याअंतरिक्षे॥२६॥ ऋषयस्त्वाप्रथमजादेवेषुदिवोमा ऋ४५
त्रयावरिम्णाप्रथंतु॥ विधर्ताचायमधिपतिश्रुतेत्वास
र्वेसंविदानानाकस्यपृष्ठेस्वर्गेलोकेयजमानंचसादयं

तु॥२८॥ अधिपत्न्यसि बृहती दिग्विश्वेते देवा अधिपतयः॥ बृहस्पतिर्हेतीनां प्रतिधर्ता॥ त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नीतां॥ शाक्वररैवते सामनी प्रतिष्ठित्या अंतरिक्षे॥२९॥ ऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथंतु॥ विधर्ता चायमधिपतिश्चते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयंतु॥३०॥ अयं पुरो हरिकेशः सू

॥४२॥

॥४३॥

र्यरश्मिस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्यौ॥ पुंजिकस्थला च क्रतुस्थला चाप्सरसौ दंक्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिः॥३१॥ तेभ्यो नमो अस्तु ते नो मृळयंतु ते नोवंतु॥ ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जंभे दध्मः॥३२॥ अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्यौ॥ मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षांसि प्रहेतिः॥३३॥

मा१

तेभ्यो नमो अस्तु ते नो मृळयंतु ते नोवंतु ॥ तेयंद्विष्मो यश्चनो द्वे
ष्टि तमेषां जंभेदध्मः ॥ ३४ ॥ अयं पश्चाद्विश्वव्यचास्तस्य रथ
प्रोतश्चासमरथश्च सेनानीग्रामण्यौ ॥ प्रम्लोचंती चानु
स ४ म्लोचंती चाप्सरसौ व्याघ्रा हेतिः सर्पाः प्रहेतिः ॥ ३५ ॥ ते
॥ ४४ ॥ भ्यो नमो अस्तु ते नो मृळयंतु ते नोवंतु ॥ तेयंद्विष्मो यश्च ॥ ४४ ॥
नो द्वेष्टि तमेषां जंभेदध्मः ॥ ३६ ॥ अयमुत्तरात्संयद्वसु
स्तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्यौ ॥ विश्वा

ची च घृताची चाप्सरसा आपो हेतिर्वातः प्रहेतिः ॥ ३७ ॥ ते
भ्यो नमो अस्तु ते नो मृळयंतु ते नोवंतु ॥ तेयंद्विष्मो यश्च
नो द्वेष्टि तमेषां जंभेदध्मः ॥ ३८ ॥ अयमुपर्यर्वाग्वसुस्तस्य
सेनजिच्च सुषेणश्च सेनानीग्रामण्यौ ॥ उर्वशी च पूर्वचि
त्तिश्चाप्सरसा अवस्फूर्जन्हेतिर्विद्युत्प्रहेतिः ॥ ३९ ॥ तेभ्यो
नमो अस्तु ते नो मृळयंतु ते नोवंतु ॥ तेयंद्विष्मो यश्च
१८ नो द्वेष्टि तमेषां जंभेदध्मः ॥ ४० ॥ अग्निर्मूर्धा दिवः ककु

सतिः पृथिव्या अयं ॥ अपां रेतांसि जिन्वति ॥
अयमग्निः सहस्त्रिणो वाजस्य शतिनस्पतिः ॥ मूर्धा
कवी रयीणां ॥ ४२ ॥ त्वामग्ने पुष्करादध्यथर्वा निरमंथ

॥४५॥ ता ॥ मूर्ध्नो विश्वस्य वाघतः ॥ ४३ ॥ भुवो यज्ञस्य ॥४५॥
रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ॥
विर दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्य
बो॰१ वाहं ॥ ४४ ॥ अबोध्यग्निः समिधा जनानां प्रति धेनुमि

वायतीमुषासं ॥ यह्वा इव प्रवयामुज्जिहानाः प्र भानवः सिस्रते ना
कमच्छ ॥ ४५ ॥ अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रात
रस्थात् ॥ समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥
॥ ४६ ॥ अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वी
ड्यः ॥ यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेवि
शे ॥ ४७ ॥ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सु
विताय नव्यसे ॥ घृतप्रतीको बृहता दिविस्पृशा द्युमद्विभा

॥५६॥

तिः भरत्तेभ्यः शुचिः॥४८॥ त्वामग्ने अंगिरसो गुहाहितमन्ववि
दंछिश्रियाणं वनेवने॥ स जायसे मथ्यमानः सहो महत्त्वामाहुः स
हसस्पुत्रमंगिरः॥४९॥ सखायः सं वः सम्यंचमिषं स्तोमं चा
ग्नये॥ वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते॥५०॥ सं
समिद्युवसे वृषन्नग्ने विश्वान्यर्य आ॥ इळस्पदे समिध्यसे
स नो वसून्याभर॥५१॥ त्वामग्ने हविष्मंतो देवं मर्तास ईळते॥
मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक्॥५२॥ त्वां चित्रश्र

॥५६॥

वस्तम हवंत विक्षु जंतवः॥ शोचिष्केशं पुरुप्रियाग्ने हव्याय वो
ळ्हवे॥५३॥ एना वो अग्निं नमसोर्जो नपातमाहुवे॥ प्रियं चे
तिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतं॥५४॥ विश्वस्य दूत
ममृतं विश्वस्य दूतममृतं॥ स योजते अरुषा विश्वभोजसा
स दुद्रवत्स्वाहुतः॥५५॥ स दुद्रवत्स्वाहुतः स दुद्रवत्स्वाहुतः॥
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानां॥५६॥ अग्ने वा प्र२
जस्य गोमत ईशानः सहसो यहो॥ अस्मे धेहि जातवेदो महि

॥५८॥

अवः॥सइधानोवसुष्कविरग्निरीळेन्योगिरा॥रेवदस्मभ्यंपु
र्वणीकदीदिहि॥५७॥क्षपोराजन्नुतत्मनाग्नेवस्तोरुतोषसः॥
सतिग्मजंभरक्षसोदहप्रति॥५८॥भद्रोनोअग्निराहुतोभ
द्रारातिःसुभगभद्रोअध्वरः॥भद्राउतप्रशस्तयः॥
भद्राउतप्रशस्तयोभद्रंमनःकृणुष्ववृत्रतूर्ये॥५९॥येनासम
त्सुसासहः॥६०॥येनासमत्सुसासहोवस्थिरातनुहिभूरिशर्ध
तां॥वनेमातेअभिष्टिभिः॥६१॥अग्निंतंमन्येयो

॥४७५

यामे

स्तंयंयंतिधेनवः॥अस्तमर्वंतआशवोस्तंनित्यासोवा
जिनइषंस्तोतृभ्यआभर॥६२॥सोअग्निर्योवसुर्गृणे
संयमायंतिधेनवः॥समर्वंतोरघुद्रुवःसंसुजातासः
सूरयइषंस्तोतृभ्यआभर॥६३॥उभेसुश्चंद्रसर्पिषोदर्वी
श्रीणीषआसनि॥उतोनउत्पुपूर्याउक्थेषुशवसस्पतइ
षंस्तोतृभ्यआभर॥६४॥अग्नेतमद्याश्वंनस्तोमैः
क्रतुंनभद्रंहृदिस्पृशं॥ऋध्यामातओहैः॥६५॥अ

॥५८॥

याह्यग्ने अत्रीभिर्दस्य दक्षस्य साधोः ॥ रथीर्ऋतस्य बृहतो बभूथ ॥६६॥ दुभिनीअर्कैर्भर्वानोअर्वीङ् स्वर्णज्योतिः ॥ अग्नेर्विश्वेभिः सुमना अनीकैः ॥६७॥ अग्निं होतारं मन्येदास्वंतं वसुं सूनुं सहसो जातवेदसं विप्रन्न जातवेदसं ॥ य ऊर्ध्वयास्वध्वरो देवो देवाच्या कृपा ॥ घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥६८॥ अग्नेत्वन्नोअंतमउत त्राता शिवाभवाव

॥५८॥

१५९

रूथ्यः ॥ वसुरग्निर्वसुश्रवा अच्छानक्षि द्युमत्तमं रयिंदाः ॥ तंत्वाशोचिष्ठदीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥६९॥ यत्र ऋषयस्तपसा सत्रमायुरिन्धाना अग्निं स्वराभरंतः ॥ तस्मिन्नहं निदधे नाके अग्निं यमाहुर्मनवस्तीर्णबर्हिषं ॥७०॥ तंपत्नीभिरनुगच्छेम देवाः पुत्रैर्भ्रातृभिरुत वाहिरण्यैः ॥ नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अरोचनेदिवः ॥७१॥ आवाचो मध्यमरुहद्भुरण्युर

श्रि १

यमग्निः सप्तर्षिभ्यः कितानः ॥ पृष्टो पृथिव्यां निहितो दविद्यु
तद्धस्पदं देणु तां ये पतन्त्यवः ॥७२॥ अयमग्निर्वीरतमो
वयोधाः सहस्रियो द्योततमप्रयुच्छन् ॥ विभ्राजमानः
सरिरस्य मध्य उप प्रयोहि दिव्यानि धामः ॥७३॥ संप्रच्य

॥५१॥

वध्वमुप संप्रयाताग्ने पथो देवयानान्कृणुध्वं ॥ पुनः कृ
ण्वाना पितरा युवानान्वातांसीत्त्वयि तंतुमेतं ॥७४॥
उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते संसृजेथामयं

चं ॥ अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमा...
श्च सीदत ॥७५॥ येन वहसि सहस्रं येनाग्ने सर्ववेदसं ॥ तेनेमं
यज्ञं नो नय स्वर्देवेषु गन्तवे ॥७६॥ अयं ते योनिरृत्वियो य
तो जातो अरोचथाः ॥ तं जानन्नग्न आरोहाथा नो वर्द्धया रयिं ॥
॥७७॥ तपश्च तपस्यश्च शैशिरावृतू अग्नेरंतःश्लेषोसि क
ल्पेतां द्यावापृथिवी कल्पेतामाप ओषधयः कल्पेतामग्न
यः पृथङ्मम ज्यैष्ठ्याय सव्रताः ॥ ये अग्नयः समनसोंत

॥५०॥

राद्यावापृथिवीइमे॥ग्रीष्मोशिराअस्तु अग्निकल्पमाना इंद्रमिव देवा अभिसंविशंतु तयादेवतयांगिरस्वध्रुवेसीदतं॥७८॥ परमेष्ठीत्वायादयतु दिवस्पृष्ठेज्योतिष्मतीं॥विश्वस्मै प्राणायापानायव्यानाय विश्वंज्योतिर्यच्छ॥सूर्यस्तेधिपतिस्तयादेवतयांगिरस्व ध्रुवासीद॥७९॥लोकंपृणछिद्रंपृणाथो सीदध्रुवात्वं॥इंद्राग्नीत्वा बृहस्पतिरस्मिन्योनावसीषदन्॥८०॥ताअस्यसूददोहसः सोमंश्रीणंतिपृश्नयः॥

जन्मंदेवानांविशस्त्रिष्वारोचनेदिवः॥८१॥इंद्रंविश्वाअवीवृधन्त्समुद्रव्यचसंगिरः॥रथीतमंरथीनांवाजानां सत्पतिंपतिं॥८२॥प्रोथदश्वोनयवसे विष्यन्यदामहः संवरणाद्व्यस्थात्॥आदस्यवातोअनुवातिशोचिरधस्मतेव्रजनं कृष्णमस्ति॥८३॥आयोष्ट्वासदनेसादयाम्यवतश्छायायां समुद्रस्यहृदये॥रश्मीवतींभास्वतीमायाद्यांभास्यापृथिवीमोर्वंतरिक्षं॥८४॥परमेष्ठीत्वासादयतुदिवस्पृ

॥५०॥

॥५९॥

छैव्यचस्वती प्रथस्वती॥ दिवंयच्छ दिवंदृᳪंह दिवंमाहिᳪं
सीः॥ विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै
चरित्राय॥ सूर्यस्त्वाभिपातु मह्यास्वस्त्याछर्दिषाशंतमे
नतयादेवतयांगिरस्वद्ध्रुवेसीदतं॥८५॥ सहस्रस्यप्रमा
सिसहस्रस्यप्रतिमासिसहस्रस्योन्मासि॥ साहस्रोसि
सहस्रायत्वा॥ ८६॥ ६५ ॥६५॥ ६५॥ ६५॥ ६५॥ ६५ ॥ ॥६५
हरिः ॐ नमस्तेरुद्रमन्यवउतोतइषवेनमः॥ बाहु

॥५९॥

[OrderDescription]
,CREATED=16.08.19 11:03
,TRANSFERRED=2019/08/16 at 11:22:31
,PAGES=49
,TYPE=STD
,NAME=S0001466
,Book Name=M-745-THAJUVED SHUKAL SAHITA PATH
,ORDER_TEXT=
,[PAGELIST]
,FILE1=00000001.TIF
,FILE2=00000002.TIF
,FILE3=00000003.TIF
,FILE4=00000004.TIF
,FILE5=00000005.TIF
,FILE6=00000006.TIF
,FILE7=00000007.TIF
,FILE8=00000008.TIF
,FILE9=00000009.TIF
,FILE10=00000010.TIF
,FILE11=00000011.TIF
,FILE12=00000012.TIF
,FILE13=00000013.TIF
,FILE14=00000014.TIF
,FILE15=00000015.TIF
,FILE16=00000016.TIF
,FILE17=00000017.TIF
,FILE18=00000018.TIF
,FILE19=00000019.TIF
,FILE20=00000020.TIF
,FILE21=00000021.TIF
,FILE22=00000022.TIF
,FILE23=00000023.TIF
,FILE24=00000024.TIF
,FILE25=00000025.TIF
,FILE26=00000026.TIF

FILE27=00000027.TIF
,FILE28=00000028.TIF
,FILE29=00000029.TIF
,FILE30=00000030.TIF
,FILE31=00000031.TIF
,FILE32=00000032.TIF
,FILE33=00000033.TIF
,FILE34=00000034.TIF
,FILE35=00000035.TIF
,FILE36=00000036.TIF
,FILE37=00000037.TIF
,FILE38=00000038.TIF
,FILE39=00000039.TIF
,FILE40=00000040.TIF
,FILE41=00000041.TIF
,FILE42=00000042.TIF
,FILE43=00000043.TIF
,FILE44=00000044.TIF
,FILE45=00000045.TIF
,FILE46=00000046.TIF
,FILE47=00000047.TIF
,FILE48=00000048.TIF
,FILE49=00000049.TIF
,